M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref. / Ser. 1004

Title: Ekaksi Ganpati Nitya Yajan.

Ekakse

1004

Complete

C

Chassai Ganpati Nitya Jagan : Title

: : : Author

: : : Editor

Sk : : : Year, Vols.

: : : Publisher

1004 : : : Remarks

५०॥ ॐ नमो गणेशाय॥ गुरुपंक्तिभ्यो नमः॥ अथातः श्रीएकाक्षरगणपतिनित्ययजनं
लिख्यते। पूर्वं नित्यादि शौचादि वास्नानं विधाय॥ धौतवाससी परिधाय आचम्य यथाकल्पि-
तं यथाशास्त्रं चंदनादिकं। शिरसि ललाटे तिलकं कुर्यात्॥ ततः सुखासने उपविश्य समंत्र-
माचमनं वार ३ ॐ गां आत्मतत्त्वाय स्वाहा। ॐ गीं विद्यातत्त्वाय स्वाहा। ॐ गूं गणतत्त्वाय स्वाहा।
क ५ इति त्रिराचमनं। ततोऽस्त्रेणात्मरक्षां कृत्वा तनुं। ततो मूलेन प्राणायामं वार १०। ॐ अंगुष्ठादि-
कनिष्ठांतं करन्यासं कुर्यात्। ॐ गां हृदयाय नमः। ॐ गीं शिरसे स्वाहा। ॐ गूं शिखायै वौष-
ट्। ॐ गैं कवचाय हुं। ॐ गौं नेत्रत्रयाय वौषट्। ॐ गः अस्त्राय फट्। अनेन मंत्रेण हृदयम्
शिरः शिखा कवचान् अस्त्रं पुनरुद्दिश्य तालत्रयपुरःसरं। ततो मातृकान्यासं कुर्या-
त्। ॐ अं ब्रह्मरंध्रे। ॐ आं मुखे। इं ईं चक्षुषोः। उं ऊं कर्णयोः। ऋं ॠं नासापुटयोः। लृं लॄं ग-
ण्डयुग्मयोः। ऐं एं ओष्ठयोर्द्वयोः। ॐ औं दंतपंक्त्योः। अं जिह्वाग्रे। अः तालुदेशे। ॐ कं खं गं घं ङं द
पं

गं

क्षिणबाहौ। ॐ चं छं जं झं ञं वामबाहौ। ॐ टं ठं डं ढं णं दक्षिणपादे। ॐ तं थं दं धं नं वामपादे। ॐ पं द-
क्षिणकुक्षौ। ॐ फं वामकुक्षौ। ॐ बं पृष्ठे। ॐ भं नाभौ। ॐ मं हृदये। ॐ यं दक्षिणपादे। ॐ रं वा-
मपादे। ॐ लं गुह्ये। ॐ वं मेढ्रे। ॐ शं करौ। ॐ षं हृदये। ॐ सं कंठे। ॐ हं भ्रूमध्ये। ॐ ळं ललाटे। ॐ क्षं
ब्रह्मरंध्रे। इति व्यापकन्यासः। ततो भूतशुद्धिं कुर्यात्। प्रथमं प्रणवेन समाच्छाद्य आत्मा द्वा-
दशांते निवेशयेत्। पादं ष्ठाकरलास्यं ह्रस्वकायं नवानकं। दंष्ट्रास्थूलप्रीतीनां दक्षिण-
कुक्षौ। विचिंतयेत्। यं इति वायुबीजं चतुर्थबिंदुलांछितं धूम्रवर्णं नाभिमंडले ध्यात्वा। यानि
तिप्रचंडवायुना तेन तदुत्पन्नेन प्रबलवायुना तेन तदाश्रयं देहं संशोषयेत्। वायुबीजं वार १२
स्मरणात्। अथ वा। ॐ रं इत्यग्निबीजं त्रिकोणमंडलं केशरवर्णं तदुपरि हृदये नाध्यस्मा-
रमित्याग्नेयबीजेन तदुत्पन्नप्रबलाग्निना तं तदाश्रयं देहं दग्ध्वा भस्मीभूतं विभाव्य १
अग्निबीजं वार १० स्मरणात्। ॐ लं पार्थिवबीजं शुक्लं एकत्र पिंडं कांचनाभं मंडलमुत्था-

द्वि

प्य लमिति पार्थिवं वार २४ स्मरणात्। ॐ वं अप्बीजेन आप्लाव्य वार २० स्मरणात्। ततो मूर्द्धि
श्वेतवर्णं पद्मस्य दलं सोममंडलमुत्पाद्य। ध्यात्वा वमित्यमृतं तद्गलितामृतप्रवाहेन
वारुणबीजं वार १६। स्मरणात्। हमित्याकाशबीजेन अंकुरादिवत् ध्यायेत्। तदाश्रयं शु-
द्धस्फटिकस्य कांतं चतुर्बाहुं गजाननं इति ध्यात्वा जपेत् वार २५ स्मरणात्। इति भूतशु-
द्धिः। ॐ श्रीएकाक्षरगणपतिमंत्रस्य गणको नाम ऋषिः गायत्री छंदः श्रीगणेशो देव-
ता गं बीजं श्रीशक्तिः सकलेप्सितकामदे सर्वे श्रीगणेश्वरप्रीत्यर्थं जपे विनियोगः।
ततो हृत्ये कर्तुं रक्तवस्त्रहाटकसन्निभे विघ्ननाशिनी चाक्षि सहितं तं समर्चयेत्। ततो
बाह्ये अस्त्रेणादिग्विदिक्षु तालत्रयपुरःसरं रक्षां कुर्यात्। ततो अस्त्रेण अर्घपात्रं प्र-
क्षाल्य हृदयेनापूर्य मूलमंत्रेण षडंगेन पूज्य मूलेन षडंगेनाभिमंत्र्य धेनुमु-
द्रां प्रदर्श्य अस्त्रेण संरक्ष्य ततः तज्जलेन पीठं आत्मानं उपहाराश्च अस्त्रेण संप्रोक्ष्य
तालत्रयपुरःसरं अवगुंठनं कुर्यात्। तत आत्मानं अर्चयेत्। पश्चात् पीठस्य पूजां

ॐ३ ६१ गं

अर्थात् आग्नेयादि कोणेषु ॐ धर्मायनमः ॐ ज्ञानायनमः ॐ वैराग्यायनमः ॐ ऐश्वर्यायनमः
ततः पूर्वादि दिक्षु ॐ अधर्मायनमः ॐ अज्ञानायनमः ॐ अवैराग्यायनमः ॐ अनैश्वर्यायनमः
मध्ये कर्णिकायां ॐ आधारशक्तयेनमः ॐ कूर्मायनमः ॐ वाराहायनमः ॐ पृथिव्यैनमः
ॐ कंदायनमः ॐ मूलायनमः ॐ नालायनमः ॐ पत्रायनमः ॐ केसरेभ्यानमः ॐ सूर्यमंडला
यनमः ॐ सोममंडलायनमः ॐ वह्निमंडलायनमः ॐ सत्वायनमः ॐ रजसेनमः ॐ तमसे
नमः ॐ आत्मनेनमः ॐ अंतरात्मनेनमः ॐ परमात्मनेनमः ॐ विज्ञानात्मनेनमः तत्रपत्रे
षु ॐ तीव्रायैनमः ॐ ज्वालिन्यैनमः ॐ नंदायैनमः ॐ भोगदायैनमः ॐ उग्रायैनमः ॐ तेजो
वत्यैनमः ॐ सत्यायैनमः ॐ विघ्ननाशिन्यैनमः एताः पूर्वादि क्रमेण नवशक्तयः अष्टा
सु दिक्षु पूज्याः पश्चात् पुष्पांजलिमापूर्य मध्ये सर्वशक्तिकमलासनायनमः त त्यक्तं
न्मूलमंत्रेण देवतामावाह्य पुष्पपीठमारोपयेत् अर्धं दत्वा जप १०० दशांशे ६२

गं

णा। गणपतिविधिः। प्रतिजप दशांश तर्पण। दशांश होमः। दशांश ब्राह्मण भोजन नो द
शांश गणपतिविधिः। अथ होम विधिः। घृताहुती तेने अष्टगुणः भवंति। १ एतयंत्रका
यंत्र अंतरे न सिद्धिः। बिल्वीर सचोखा मध्ये हवन कीजे १०८ स्त्री थवा पुरुष आकर्षि
कीजे। गणपति आगल मांडीये मांषणनी अग्नि कीजे जहनुं नाम लेइ आलिखे करी
जे जप १०८ नेस्त्री आवे देहि घृत मधु मस्त क जपे २१० अन्या वश्यथाए अनक स्य
वीर हुये। प्रीता अने राइ पोरी गणीनी घृतन घृत मधु आज्य १०८ रीगणीने फलने घ
जीये ये माणरा के नाम वश्य थाए। च तु थी न दिवस तिल घृत मधु होम कीजे ८ म हा
सैरोग जाए राजा वश्य थाए स्त्री वश्य थाए। आ वश्य थाए १०८ घृत मधु तिलहो
माने आमीत रखा नीए चीत पत नीए इक्का वी ए इति विधिः।
गानी ऊपं न्विदये ग्रायथे संस्कृय तेन नक्या प्रण मफल वुनः ॐ नः।। साधनानी

वसर्वे विघ्नोमे तस्माध्यनम्तु तमै ध्मयये न्मनसामंत्रैर्याचाने व प्रकृ राये
वानंदरूपयाष्ठिरो ज्जिवांदंतो ष्ठौन्निवचा न्ये नत्राःश्रनेनपरिणाजर्पं ऊर्या
त्ता॥ ततः परांमुखवऊँ पंकुजांऊर्यान्तेपरांमुखवाघें चदत्वावि स्तुजेत्ताम्र
नमंत्रेणस्वहृदि विन्यसेनेड्रत्येकोदारणमापनिनि त्याचैनं॥ समाप्त
मिति॥ शुभं नवतु॥ श्री॥ रा॥ म॥॥ ठ॥ श्री॥ ठठठ॥ श्रीरामः